CHUNILAL GANDHI VIDYABHAVAN
SURAT.

Manuscripts Library

S D · P · 13

Coll. No. ૨૨૦

Title Batukabhairava-stotra

CHUNILAL GANDHI VIDYABHAVAN, SURAT

Shastri Dinmanishankar Pustak-Bhandara

No.: 220 Subject: Tantra.

Title: Batuka Bhairava Stotra

Author: — Scribe: —

Date of the work: — Date of the Ms.: —

Place of the work: — Place of the Ms.: —

Size: 6·5 length · 2" Extent: 14 foll. no 3 missing

Language: Sanskrit. Script: Devanagari

Remarks: incomplete. Foll. no 3 missing

षट्
१

॥ अथ षटकर्म [illegible] ॥

१

ॐ श्रीगणेशाय नमः ॥ श्रीबटुकभैरवाय नमः
मेरुपृष्ठे सुखासीनं देवदेवं त्रिलोचनं ॥ शंकरं प
बप्र रिपृच्छांभि पार्वती परमेश्वरं ॥ श्रीपार्वत्युवा
च ॥ भगवन्सर्वधर्मज्ञ सर्वशास्त्रागमादिषु
आपदुद्धारणं मंत्रं सर्वसिद्धिप्रदं नृणां २
सर्वेषां चैव भूतानां हितार्थं वांछितं मया
विशेषतस्तु राज्ञां वै शांतिपुष्टिप्रसाधनं व्र वर्धनं
अंगन्यासकरंन्यासदेहन्याससमन्वितं व

बटु० कुमर्हसिद्देवेशा ममहर्षविवर्धनं ॥ ईश्वरउवा
२ च ॥ शृणुदेविमहामंत्रं मापदुद्धारहेतुकं सर्व
दुःखप्रशमनंसर्वशत्रुविनाशनं ५ अपस्मा
राद्दिरोगाणां ज्वरादीनांविशेषतः नाशनंस्म
तिमात्रेणमंत्रराजमिमंप्रिये ६ ग्रहराजनया
नांचनाशनंसुखवर्धनं स्नेहाद्वक्ष्यामितेमंत्रं
सर्वसारमिमंप्रिये ७ सर्वकामार्थदंदेविरा
ज्यभोगप्रदंनृणां आपदुद्धारणंमंत्रंप्रवक्ष्या २

मिविशेषतः ८ प्रणवंपूर्वमुद्धृत्यदेवीप्रणवमु
द्धरेत् बटुकायेतिवैपश्चादापदुद्धारणायच
९ प्रणवंपूर्वं कुरुद्वयंततःपश्चाद्बटुकायपुनर
वदेत् देवीप्रणवमुद्धृत्यमंत्रोद्धारमिमंप्रि
ये १० मंत्रोद्धारमिमंदेवीत्रैलोक्येचापिदुर्लभं
अप्रकाश्यमिमंमंत्रंसर्वशक्तिसमन्वितं ११
स्मरणादेवमंत्रस्यभूतप्रेतपिशाचका विद्रवं
त्यतिभीतावैकालरुद्रादिवप्रजा १२ पठे

ये ह्या पाठ[illegible]ना पि पूजये ह्यापि हस्तकं नाग्निचौर
भयं तत्र ग्रहराजभयं तथा १७ न च मारीभयं
किंचित् सर्वत्र सुखवान्भवेत् आयुरारोग्य
मैश्वर्यं पुत्रपौत्रादिसंपदः भवंति सततं तस्य
पुस्तकस्यापि पूजनात् ॥ पार्वत्युवाच ॥ य एष भैर
वो नाम आपदुद्धारको मतः त्वया च कथि
तो देव भैरवः कल्प उत्तमं १८ तस्य नामा सह

स्राणि अयुतान्यर्बुदानि च सारभूतस्य तेषां
वै नामाष्टशतमुत्तमं ॥ यानि संकीर्त्य मर्त्यः स
र्वदुःखविवर्जितः ॥ सर्वान्कामानवाप्नोति सा
धकः सिद्धिमेव च ॥ ईश्वर उवाच ॥ शृणु देवि व
क्ष्यामि भैरवस्य महात्मनः आपदुद्धारकस्ये
ह नामाष्टशतमुत्तमं ॥ १९ ॥ सर्वपापहरं पुण्यं सर्वा
पत्तिनिवारणं ॥ सर्वकामार्थदं देवी साधका
नां सुखावहं ॥ २० ॥ सर्वमंगलमांगल्यं सर्वमा

बटु॰
४

धिविनाशनं आयुस्करं पुष्टिकरं श्रीकरं चय
शस्करं २१ नामाष्टशतकस्यास्य छंदोनुष्टुप्
प्रकीर्तित बृहदारण्यकोनाम ऋषिर्देवोथ
भैरव २२ अष्टबाहुंत्रिनयनं मिति बीजं शा
माहितं शक्तिकं कीलकं शेषमष्टसिद्धोन
युज्यते २३ भैरवं मूर्ध्नि विन्यस्य ललाटे भीम
दर्शिनं नेत्रयोर्भूतहननं सारमेयानुगं भ्रुवोः
२४ करणयोर्भूतनाथं च प्रेतवाहं कपोल ४

योः नासापुटोष्टयोश्चैव भस्मांगं सर्पभूषणं २५ अ
नादिभूत मांसे च शक्तिहस्तं गले न्यसेत् स्कंद
योर्दैत्यशमनं बाह्वोरतुलतेजसं २६ पाण्योः क
पालिनं न्यस्य हृदये मुंडमालिनं शांतं वक्षस्थ
ले न्यस्य स्तनयोः कामचारिणं २७ उदरे च सदा
तुष्टं क्षेत्रेशं पार्श्वयोस्तथा क्षेत्रपालं पृष्टदेशे
रां॰ग क्षेत्रं[illegible]नाभिदेशके २८ पापौघनाशनं कट्यां

बटुकं लिंगदेशे के गुह्ये रक्षाकरं न्यसेत् नाभौ वीर
कलोचनं २९ जानुनोः क्षेत्रपालं च जंघयो रक्तपादि १२
नं गुल्फयो पादुकासिद्धिं पादपृष्ठे सुरेश्वरं ३०
आपादमस्तकं चैव आपदुद्धारकं तथा पूर्वे कम
रुहस्तं च दक्षिणे दंडधारिणं ३१ खड्गहस्तं पश्चि
मायां घंटाकादि निरुत्तरे आग्नेय्यामग्निवर्णं च
नैऋत्यां च दिगंबरं ३२ वायव्ये सर्वभूतस्य मीशा

न्यां चाष्टसिद्धिदं ऊर्ध्वे खेचरिणं न्यस्य पाताले
रौद्ररूपिणं ३३ एवं विन्यस्य देहे स्वे षडंगे सुत
तो न्यसेत् रुद्रमंगुष्ठयोर्मध्ये न्यसेत्तर्जन्योस्तु
शिखि सखं ३४ शिवं मध्यमयोर्न्यस्य नाम्निकयोः म
स्तु त्रिशूलिनं ब्रह्माणं च कनिष्ठायां तलयोः
त्रिपुरांतकं ३५ मंत्रात्रीनंकरांगेतु करपृ
ष्ठे दिगंबरं हृदये भूतनाथाय आदिनाथाय

बटु० ६ मूर्धनि ३६ आनंदपदवीयिनाथायाचक्रि
खासुख सिद्धसाधकनाथाय कवचे वन्यसेत्त
था निसीमानंदनाथाय अस्त्रे चैव प्रयोजये
त् ३८ एवंन्यासविधिंकृत्वायथावद्वदनं त
रं ध्यानं तस्य प्रवक्ष्यामि यद्ध्यात्वा पठेन्नरः ३९
शुद्धस्फटिकसंकाशं सहस्रादित्यवर्चसं द्वि
बाहुं दक्षबाहुं च दिव्यांबरपरिग्रहं नीलजी ६

मूतसंकाशं नीलांजनसमप्रभं ४० अष्टबाहुं
त्रिनयनं चतुर्बाहुं द्विबाहुकं दंष्ट्राकरालवदनं
नूपुरारावसंकुलं भुजंगमेखलं देवमग्निवर्णशि
रोरुहं ४१ दिगंबरं कुमारेशं बटुकाख्यं महाबलं
खट्वांगमसिपाशं च शूलं दक्षिणभागतः ४२ डु
मरुं च कपालं च वरदं भुजगं तथा आत्मवर्णसमोपे
तं सारमेयसमन्वितं ४३ ध्यात्वा जपेत्सुसंहृष्टः
सर्वान्कामानवाप्नुयात् अथ ध्यानं करकलि

तकपालं कुंडली दंडपाणीस्तरुणि तिमिरनी
लोव्यालयज्ञोपवीती क्रतुसमयसपर्या वि
घ्नविछेदहेतुर्जयति बटुकनाथः सिद्धिदः सा
धकानां ॥४॥ ॐ अस्य श्री आपदुधारण बटु ह्रीं
कभैरवस्तोत्रमंत्रस्य वृहदारंण्यको नाम ऋषिः
बटुकभैरवो देवता अनुष्टुप छंदः ह्रीं बीजं ब
टुकायेति शक्तिः प्रणव कीलकं मम धर्मार्थका
ममोक्षार्थे जपे विनियोगः ॐ ह्रौं बां अंगुष्टाभ्यां

नमः ॐ ह्रीं बीं तर्जनीभ्यां नमः ॐ ह्रूं बूं मध्यमाभ्यां
नमः ॐ ह्रैं बैं अनामिकाभ्यां नमः ॐ ह्रौं बौं क
निष्टिकाभ्यां नमः ॐ ह्रः बः करतलकरपृष्टा
भ्यां नमः अथ अंगन्यासः ॐ ह्रां बां हृदयाय न
ह्रीं मः ॐ ह्रीं बीं ~~तर्जनीभ्यां नमः~~ शिरसे स्वाहा ॐ ह्रूं बूं ह्रूं
शिखायै वषट् ॐ ह्रैं बैं कवचाय हुं ॐ ह्रौं बौं
नेत्रत्रयाय वौषट् ॐ ह्रः बः अस्त्राय फट्
त्रिमूर्ति अथ ध्यानं तत्रो स्वात्त्विकं वंदे बालस्फटि

बटु० कसद्दशांकुंडलोद्भासिवक्त्रं दिव्याकल्पैर्नव
८ मणिमयैः किंकिणीनूपुराद्यैः दीप्ताकारं विश
दवदनं सुप्रसन्नं त्रिनेत्रं हस्ताब्जाभ्यां बटुकम भ
निशं शूलदंडौ दधानं १ अथ राजसं उद्यद्भा
स्करसंनिभं त्रिनयनं रक्तांगरागस्रजं स्मेरा
स्यं वरदं कपालमभयं शूलं दधानं करैर्नील
ग्रीवमुदारकौस्तुभधरं सीतांशुचूडोज्ज्वलं
बंधूकारुणवाससं भयहरं देवं सदा भावये ८

२ अथ तामसं ध्यायेन्नीलाद्रिकांतं शशि
सकलधरं मुंडमालामहेशं दिग्वस्त्रं पिंगके
शं डमरुमथ सृणिं खड्गशूलाभयानि नागं
घंटाकपालं करसरसिरुहैर्बिभ्रतं भीमदं
ष्ट्रं सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किं
किणीनूपुराद्यैः ३ इति त्रिमूर्तिध्यानं ध्ये
यांति पञ्चाननस्यं शशिशकलधरं मुंडमा
लामहेशं दिग्वस्त्रं पिंगकेशं डमरुमथस

ब

णंखड्गशूलान्वयानिनागंपात्रंचघंटांनहलि
नद्भुतकरंशंकुशंवामभागे नागालंकार
युक्तंस्फटिकमणिनिभंनौमितंत्रिशिवारव्यं
इतिध्यानं अथमंत्रः ॐह्रींवटुकायआ
पदुद्धारणायकुरुकुरुवटुकायह्रींॐह्रीं
ह्रौंनमःशिवायॐनमोवटुकायः अथनम
स्कारमंत्रंः अतितीक्ष्णमहाकायकल्पां
तदहनोपमः भैरवायनमस्तुभ्यंमनुज्ञांदा

तुमर्हसि ॥ ७ ॥ ॐह्रींह्रौंनमःशिवायः ॐभै
रवोभूतनाथश्चः भूतात्माभूतभावनःक्षेत्रज्ञ
क्षेत्रपालश्चक्षेत्रदःक्षत्रियोविराट् स्मशान
वासीमांसाशिमांसाशिखर्पराशीस्मरांतकृ
त् रक्तपःपानपःसिद्धःसिद्धिदःसिद्धिसेवितः २
३ कंकालःकालशमनःकलाकाष्ठातनुःकविः
त्रिनेत्रोबहुनेत्रश्चतथापिंगललोचनः ३
शूलपाणिःखड्गपाणिःकंकालीधूम्रलो

बटु०
१०

चनः अभिरुर्भैरवीनाथो भूतपो योगिनी
पतिः ४ धनदो धनहारी च धनवान् प्रतिभा
नवान् नागहारो नागपाशो व्योमकेशः क
पालभृत् ५ कालः कपालमाली च कमनीयः
कलानिधिः त्रिलोचनोज्वलन्नेत्रस्त्रिशिः
खी च त्रिलोकपः त्रिनेत्रतनयो डिंभः शांत
शांतजनप्रियः बटुको बटुकेषश्च खट्वां
गवरधारकः भूताध्यक्षः पशुपतिर्भिक्षुकः १०

परिचारकः धूर्तो दिगंबरः शूरो हरिणः पांडुलो
चनः प्रशांतः शांतिदः सिद्धः शंकरप्रियबांधवः
अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तोमयः ७ पो
अष्टाधारः षडाधारः सर्पयुक्तः शिखीसखः
१० भूधरो भूधराधीशो भूपतिर्भूधरात्मजः
कंकालधारी मुंडी च नागयज्ञोपवीतवान् ११
जृंभणो मोहनः स्तंभी मारणः क्षोभणस्तथा
शुद्धो नीलांजनप्रख्यो दैत्यहा मुंडभूषितः

१२ बलिभुग्बलिभुङ्नाथो बालो बालपराक्र
मः ८ सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः
१३ कामी कलानिधिः कांतो कामिनी वशकृ
द्वशी सर्वसिद्धिप्रदो वैद्यः प्रभुर्विष्णुरितीव ही
१४ अष्टोत्तरशतेनाम्नां भैरवस्य महात्मनः
मया ते कथितं देवी रहस्यं सर्वकामदं १५
य इदं पठते स्तोत्रं नामाष्टशतमुत्तमं न तस्य
दुरितं किंचिन्न रोगेभ्यो भयं तथा १६ न च

मारीभयं तस्य ग्रहराजभयं तथा न शत्रुभ्यो भ
यं किंचित्प्राप्नुयान्मानवः क्वचित् १७ पातका
नां भयं चैव यः पठेत्स्तोत्रमुत्तमं मारीभये राज
भये तथा चौराग्निजे भये उत्पातके महाघो
रे तथा दुःस्वप्नजे भये बंधने च तथा घोरे पठेत्स्तो
त्रमनुत्तमं सर्वं प्रशममायाति भयं भैरवकीर्त्ति
नात् १८ एकादशसहस्रं तु पुरश्चरणमुच्य
ते यस्त्रिसंध्यं पठेद्देवी संवत्सरमतंद्रितः

१० ससिद्धिंप्राप्नुयाद्दिष्टांदुर्लभामपिमानव
षण्मासाद्भूमिकामस्तुजपित्वाप्राप्नुया:
न्महीं राजशत्रुविनाशार्थंजपेन्मासाष्टकंपु
न २१ राज्ञोवारत्रयंचैवनाशायतेवशत्रवा
र् जपेन्मासत्रयंवैकोराजानंवशमानयेत्
धनार्थीवसुतार्थीवदारार्थीयस्तुमानवः
जपेन्मासत्रयंदेविवारमेकंतथानिशि ध
नंपुत्रांस्तथादारान्प्राप्नुयान्नात्रसंशयः १२

रोगीरोगात्प्रमुच्येतबद्धोमुच्येतबंधनात् २३
भीतोभयात्प्रमुच्येत देवीसत्यंनसंशयः नि
गडैश्चापियोबद्धः कारागृहनिपातितः २५ शृं
खलाबंधनंप्राप्य पठेद्वैवदिवानिशिः यावा
न्नसमीहतेकामांस्तांस्तांप्राप्नोत्यसंशयः
२६ अप्रकाश्यंपरंगुह्यंनदेयंयस्यकस्यचित्
दुकुलीनायशांतायक्रमवेदनवर्जितेः द्य
स्तोत्रमिदंपुण्यंसर्वकामफलप्रदं भैरवोपि

७।

प्रसन्नोभूत्स सर्वलोकमहेस्वरः एवंस्तुत्वात
तोदेवी नामाष्टशतमुत्तमं संतोषंपरमं प्राप
भैरवस्य महात्मनः २९ राजापैरयान्नस्या प
सदा सर्वेश्वरेश्वरी ३० इति श्रीरुद्रयामले
विश्वसारोद्धारे उमामहेश्वरसंवादे आपदु
द्धारणे नाम बटुकभैरवस्तोत्रं संपूर्णम् स्तु
मोव्रणो गिरिराजानं भगवती विश्वंभे रात्रो

जनं स्तुतात्वादशामामित्रान्यनिमिषा क्रीडादि
कर्मादिकाः वेदा ह्रीं वपिसायि स्तुबक बटुको
रेमेपंमहाधृये देवः कल्पादितावेरान नामयेः
भोक्ता महाभैरवः ॥ १ ॥ त्र्यानीलं कृतं तमलक
करं कवर्णमोहनीकृतं रूतमनोज्ञमुखारविं
दं कल्याणकीर्तिकमनीयकपालपालिं वंदामु
हे बटुकनाथममीष्टसिद्ध्येः २ ककाराः कक
स्मीरणः कंदहनः कपश्चविश्वंभरः कव्रह्माः

बटु॰
१४

=प्रतुदित=

कजनार्द्दनः केतरणीः केउग्रदेवासुरा कल्पां
नेत्रनन्दनतः श्री सिद्धयोगेश्वरः क्रीडानाटक
नायको विजयते देवो महाभैरवः २ फणिधर
फणिनाथो देवदेवाधिनाथ क्षितिधर क्षिति
नाथो वीरवैतालनाथः निधिपति निधिनाथो
योगिनी योगनाथ जयति बटुकनाथः सि
द्धिदः साधकानां ४ शिवशिवशिवशिवशि
वः राम राम राम राम राम राम राम राम रामरम १४